CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
S.D.P.B.
Coll. No. 891.

Title Pauṣa śatalā Ekadaśī kathā

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 391 Subject: Payranic Rit.

Title: Pauṣī safalā Ekadaśī katha.

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 9.5" by 5.3" Extent: 4 foll

Language: Sanskrit. Script: Devanāgarī

Remarks: —

४ पोषीत्तल्हाएकादशीनीकथापत्र ४

॥श्रीगणेशायनमः॥ युधिष्ठिरउ०॥ पोषस्यशुक्लपक्षेतुद्वादशीकाभवेन्नृ
प॥ किंनामकोविधिस्तस्याकोदेवस्तत्रपूज्यते॥१॥ एतदाचक्ष्वमेराजन्वि
स्तरेणयथातथं॥ श्रीकृष्णउ०॥ कथयिष्यामिराजेंद्रभवतःस्नेहकारणात्॥
नतथातुष्टिमायामियज्ञैश्चबहुदक्षिणैः॥२॥ यथाहंतुष्टिमायामिएकाद
शीव्रतेनवै॥ तस्मात्सर्वप्रयत्नेनकर्त्तव्यंहरिवासरं॥३॥ पौषस्यशुक्लपक्षेतु
द्वादशीयाभवेद्दिह॥ तस्याश्चैवापिमाहात्म्यंशृणुष्वैकाग्रमानसः॥४॥ अ
ष्टकायाश्चमाहात्म्यंनोराजन्नेकादश्यास्तथैवच॥ तासांचैवापिसर्वासां
विकल्पंनैवकारयेत्॥५॥ तथाप्येकादश्याःशृणुराजन्कथानकं॥ अतः
परंप्रवक्ष्यामिपौषस्यशुक्लपक्षजां॥ लोकानांतुहितार्थायकथयामिवि
धिंतथा॥ शुक्लपक्षेतुपौषस्यपुत्रदानामनामतः॥६॥ नारायणोधिदेव १
स्यात्तत्पूजयेच्चप्रयत्नतः॥ सर्वेणविधिनाराजन्कर्त्तव्यैकादशीजनैः

॥८॥नागानांचयथाशेषःपक्षिणांगरुडोयथा॥देवानांचयथाश्रे
ष्ठोद्विपदांन्नाब्रह्मणोयथा॥९॥यथाश्वमेधोयज्ञानांतीर्थानांगरु
डोयथा॥तथाव्रतानांसर्वेषांएकादशीन्टपोत्तम॥१०॥वाराहपुरा
णे॥तेननाममनोराजनन्दृष्ट्याश्चैवापिसर्वशः॥हरिवासरसंज्ञी
नाववर्त्ततेयमहायशाः॥११॥सफलानाममनामेतितस्याःपुण्यंस्ट
णुष्वतत्॥फलैर्मंत्रिसंयुत्राजन्नतथैवाश्चावचैरपि॥१२॥नालि
केरस्यफलैश्चैवतस्यपुण्यंस्टणुष्वतत्॥जंबीरैडाडिमीवापितथाइ
गिफलैरपि॥१३॥लवंगैर्विविधैश्चैवतस्यपुण्यंस्टणुष्वतत्॥त
समंनास्तिविज्ञानेतीर्थैचतत्समेनहि॥१४॥नहितत्सहशांकिं
चिद्दिल्लोकेपरत्लच॥पंचवर्षसहस्राणिव्हतेनतपसाफलं॥१५॥
तत्फलंसवाप्नोतिएकादश्याःश्रनावतः॥स्रुयतांराजशाईल

सफलायाः कथानकं ॥१६॥ चंपावतीति विख्याता पुरा माहि
ष्मतीति च ॥ महिष्मतस्य राजर्षेश्चत्वारश्च सुताऽनवत् ॥१७॥
तेषां मध्ये तु ज्येष्ठो यो महापापसमन्वितः ॥ परदाराभिगामी च
वेश्यारतरतिः सदा ॥१८॥ पितुर्द्रव्यं पापिष्टो गमयत्यपकर्म
णा ॥ असद्वृत्तिरतो नित्यं नित्यं च द्विजनिंदकः ॥१९॥ स वैष्णवा
नां देवानां नित्यं निंदारतोऽभवत् ॥ ईदृशं तु तदा दृष्ट्वा पुत्रं मा
हिष्मतस्तदा ॥२०॥ लुंभको नाम नाम्नेति लक्षितवांस्तस्य कर्म
तः ॥ राज्यान्निःकासितस्तेन तथा वै सर्वबंधुभिः ॥२१॥ तस्या
पि परिवारैस्त्यक्तो राजंस्त्यया द्वितैः ॥ लुंभकोपि तदात्मकां
श्चिंतयामास एककः ॥२२॥ मया च क्रियते किं वै त्यक्तेन स ॥२॥
र्वबांधवैः ॥ ॥ तदा चैव पुरं सर्वं त्याच ॥ स्या द्वेता पितुश्च मे ॥२३॥

इत्येवंसमतिंक्त्वात्लुब्धकोदेवया।ततः॥निर्जगामतत्तस्तस्मात्क्रतोसौगहनेवने॥२४॥जीवविद्यातकरोनित्यंनित्यंपापपरायणः॥सर्वंचनगरंतेनव्याप्तितंपापकर्मणा॥२५॥गृहीतस्यैवमुक्तस्यराज्ञामाक्षिप्तेनतु॥जन्मांतरेणपापेनराज्यभ्रष्टःसपापकृत्॥२६॥आमिषेनिरतोनित्यंरतावैफलंनव्रते॥आश्रमेतस्यदुष्टस्यवासुदेवसमोततः॥२७॥अश्वत्थोवर्त्तितत्रजीर्णश्चिवक्रवार्षिकः॥देवत्वंवर्त्ततेतत्रैस्यवृक्षस्यवर्त्ततेचवनेमहान्॥२८॥तत्रैवचावसन्नित्यंलुब्धकोपापबुद्धिमान॥सकश्चित्कालपर्यंतंवनेचैकोवसत्तदा॥२९॥दैवेनविहितंचैवकस्माच्चित्तापसंचयात्॥पौषस्यचलत्पक्षेतुसफलायादिनेतथा॥३०॥दशम्यादिवसेरात्रिशायांशीतपाडितः॥पाठ्यमानश्चशीतेनअश्वत्थस्यसमीपतः॥३१॥ननिद्रानसुखंतस्यमृतप्रायइवाभवत्॥नाऽस्तेदर्शनंदीनएवंचगमिता निशा॥३२॥ना

नुदयेचतेनापिनसंज्ञाप्राप्यतेतदा॥लुंनकोत्तेगेसंज्ञस्तकसफलाया
दिनेनवत्॥३३॥प्राप्यसंज्ञांततःसोपिचासनाऽदतिष्ठत॥सवलि
तश्चपदान्यौंसस्खलितश्चमुहुर्मुहुः॥३४॥वनमध्यगतस्तत्रक्षुत्पि
पासासमन्वितः॥नशक्तिर्जीवघातेचलुंनकस्यदुरात्मनः॥३५॥फ
लानिचतदाराजन्नजहारसलुंनकः॥यावत्समागतस्तत्रतावदस्तं
गतोहरिः॥३६॥किंनविष्यतितातेतिविलप्यपातिदुःखितः॥फला
निताससर्वाणिहृक्षमूलेनिवेश्यसः॥३७॥इतिवास्तंततःप्रोवेफलै
स्तुप्रीयतांहरिः॥इत्युक्त्वालुंनकश्चैवनननिद्रामुपजग्मिवान्॥३८॥
रात्रौजागरणंराजन्लुंनकस्यवभूवह॥फलानोध्यजनेमनेसफ
लामाद्दिनेहरिः॥३९॥लुंनकेनापिसद्भावात्अकस्मात्कृतमुत्तमं॥ ॥३॥
तेनपुण्यप्रभावेनप्राप्तंराज्यमकंटकं॥४०॥रवेश्चत्यफदयोया

वत्तावदास्तजगामह ॥ दिव्यीरूपंच तत्तस्यत्तुंनकस्यमहात्मनः ॥ ४१ ॥ दिवश्चै
वमहाराजवागुवाचाशरीरिणी ॥ राज्यंप्राप्स्यसिपुत्रत्वंसफलायाःप्रसादतः
॥ ४२ ॥ तथेत्युक्त्वा तु सोप्यत्रदिव्यरूपधरोनवत् । ततंराज्यंतु तेनैव तेनैव
स्तुवकुन्यपि ॥ ४३ ॥ हरिवासरसंलीनविष्णुनक्तिरतःसदा । नमेजातस्यपु
त्रादिनदारानसुखंतथा ॥ ४४ ॥ पश्चाद्राज्यंतुसत्यत्का पुत्रेराज्यंनिवेश्यचाग
तःगस्तस्यसांनिध्यंगत्वायत्र न २७ शोच्यते ॥ ४५ ॥ एवंयेवैप्रकुर्वंतिसफलैका
दशीन्नृप ॥ इह लोके यशःप्राप्यमृतोमोक्षमवाप्नुयात् ॥ ४६ ॥ धन्यास्तेमानवा
लोकेसफलायांतुयेरताः ॥ तेषांजन्मैवसफलंएवमेवनसंशयः ॥ ४७ ॥ प
ठनाश्रवणाद्वापिवाजपेयफलंलभेत् ॥ ॥ इतिश्रीसौपर्णपुराणेपौषीसफ
लाएकादशीतत्त्वासंपूर्णा ॥ श्रीगणेशायनमः ॥

॥पोषीत्रस्लाएकादशीनीकथापत्र॥